प्र॰ श्रीगणेशायनमः॥ॐनमःशिवाय॥अस्यश्रीप्रत्यंगिरास्तोत्रमंत्रस्य
१ वामदेवऋषिः॥अनुष्टुप्छंदः श्रीप्रत्यंगिरादेवता ह्रींबीजं ह्रूंश
क्तिः क्लींकीलकं ममाभीष्टसिध्यर्थेजपेविनियोगः ॐह्रांअं
गु॰ ॐह्रींतर्ज॰ ह्रूंमध्यमा॰ ह्रैंअना॰ ह्रौंकनि॰ ॐह्रः कर॰ एवं
हृदयादि अथध्यानं ॐध्येकपालंडमरुंत्रिशूलंबिभ्रतीचंद्र
कृतंसा पिंगोर्ध्वकेशीसितभीमदंष्ट्राभूयाद्विभूत्यैममकामद
1 ध्ये ॐनमःप्रत्यंगिरायै मंदरस्थंसुखासीनंभगवंतंमहेश्वरं शिवः

प्र॰ तांचविद्यांसुरश्रेष्ठकथयस्वममप्रभो ६ श्रीभैरवउवाच साधु
२ साधुमहाभागेजंतूनांहितकारिणि त्वद्वचनात्स्मरेशानिकथया
भिन्नसंशयः ७ देवीमस्यंगिराविद्यासर्वग्रहनिवारिणी मर्द्दिनी
सर्वदुष्टानांसर्वपापविमोचनी ८ स्त्रीबालप्रभृतीनांचजंतूनां
हितकारिणी सौभाग्यजननीदेवीबलपुष्टिकरीसदा ९ चतुष्प
थेषुगोष्ठेषुवनेषूपवनेषुच स्मशानेदुर्गमेघोरेसंग्रामेशत्रुसं
2 कटे १० राजद्वारेचदुर्भिक्षेमहाभयउपस्थिते पठितापाठि शिवः

समुपागम्यैकांचरणौ पार्वती परिपृच्छति श्रीपार्वत्युवाच धारणी परमा विद्या प्रसंगिरा महोदया नरनारी हितार्थाय बालानां र क्षणाय च २ राज्ञां मांडलिकानां च दीनानां च महेश्वरा विदुषां च द्विजातीनां विप्रो येणार्थसाधिनी ३ महाभयेषु घोरेषु विद्युद ग्नि भयेषु च व्याघ्रदंष्ट्रीकरीणां तेनदीनदसमुद्रके ४ अभि चारेषु सर्वेषु रणे राजभयेषु च पठितां सर्वकैनैव कारयेत्सा न्मनोरथान् ५ सौभाग्यजननी देवी नृणां वश्यकरी तथा

प्र॰ सदाविद्याप्रत्यंगिराशिवोदिता १६ सर्वार्थसिद्धिदानित्यंविद्येयंप
३ रमास्मृता श्रीमत्ताघोररूपेणभाषितासघोररूपिणी १७ प्रत्यं
गिरासदाप्रोक्तारिपुंहन्यान्नसंशयः। हरिचंदनमिश्रेणरोचनाकुं
कुमेनच १८ लिखित्वाभूर्जपत्रेतुधारणीयासदानरैः पुष्पैर्धू
पैर्विचित्रैश्चबल्युपहारपूजनैः १९ पूजयित्वायथान्यायंशातकुंभे
3 नवेष्टयेत् धारयेद्यइमांविद्यांनिश्चितंरिपुनाशनं २० विलयं
यांतिरिपवःप्रत्यंगिराभिधारणात् यद्यात्स्पृशतिहस्तेनयद्यत्खा शिवः

ताविद्यासर्वकार्यकरीस्मृता ११ विद्यानामुत्तमाविद्यावादिनाधा
रितानरैः लिखित्वाचकरेकंठेवाहौशिरसिधारयेत् १२ मुच्य
तेचमहारोगैर्मृत्युभीतिदुरासदैः ग्रहाश्चैवाष्टसिद्धाश्चदेवराक्ष
सपन्नगाः १३ नतस्यपीडांकुर्वंतियेचान्येपीडकाग्रहाः कुमं
त्राद्यभिचाराश्चनतस्यप्रभवंतिवै १४ नित्यंचधार्यमाणस्य
त्वस्त्रनत्वंप्रकल्पयेत् योधारयेद्रोगयुक्तस्तस्यरक्षाभवेद्ध्रु
वं १५ धारितावाचिताविद्यासर्वसिद्धिकरीस्मृतायस्यांगस्था

प्र० द्यांसिद्धिंदेव्याःप्रसादतः चराचरमिदंसर्वंसशैलवनकाननं २७
४ नरनारीसमाकीर्णंसाधकस्यचसुव्रते सर्वदावशतांयांतिजपमान
स्यनित्यशः २८ गोलकस्यप्रभावेनप्रत्यंगिराप्रभावतः त्रिपुरस्य
मयादग्धद्रमांविद्यांचविभ्रता २९ निर्जिताश्चासुराःसर्वेसिद्धवि
द्याधरास्तथा गोलकंसंप्रवक्ष्यामिभेषजानिचसुव्रते ३० वि
5 ष्णुक्रांतामदनकंकुंकुमंरोचनंतथा अरुष्करंविषारिष्टंसिद्धार्थे
मालतीतथा ३१ एतद्द्रव्याणिदेवेशिगोलमध्येनिधापयेत् समस्तं शिवः

हतिजिह्वया २१ अस्तंतत्कुदेत्सर्वैर्नापमृत्युः कदाचन कर्मणायाज
पेद्यद्यत्कर्मिमंद्दारुणं सदा २२ भक्षितं जरयेद्याधुनरस्यान्नप्यसुभक्ते
तथास्यांपहूयमाना यांजीर्यतेनात्र संशयः २३ नृणांरक्षाकरीदेवी
सर्वसिद्धिकरीस्मृता सर्वमंत्रशिलासीच गोलकस्यान्नराणरा २४ स
र्वव्याधिहरा विद्यासिद्धिदात्रीमहेश्वरी प्राज्ञोतिवसुधांसर्वांरिपुह
स्तगतांलिमां २५ वश्यासन्तस्येवानिशंनिशत्रवः प्राणहारकाः
भवंति वशगास्तस्य सौंदर्यश्चारुदर्शनाः २६ अभ्यस्यतांयानिनि

प्र॰ २ ॐ यसर ॐ पिवर ॐ नाशाय २ ॐ भ्रामयर ॐ दर २ ॐ दारय २ ॐ द्रा
५ वयर ॐ विद्रावयर ॐ त्रासयर ॐ ममशत्रून् भक्षयर ॐ त्वंमां धारकं
सपरिवारंरक्षर स्वाहा ॐ ॐ ऐं ऐं सर्वभूतभयोपद्रवेभ्योमहामेघौ
घसंवर्त्ताग्निविद्युदर्कसंवर्त्तकपर्द्दिव्यंकनकांभोरुहविकचप
द्ममालाधरशितिकंठकपालछत्रव्याघ्राजिनककुभरवट्वांगधरप
5 रमेश्वरप्रिये ॐ ममशत्रून् ॐ ह्रिं द्रिर ओं भिं द्रिर ॐ विद्रावयर ॐ देव
पितृपिशाचनागासुरगरुडकिंनरविद्याधरगंधर्वयक्षराक्षसलो श्रीवः

धारयेन्मंत्रीसाधको मंत्रवित्सदा ॥३२ अधुनासंप्रवक्ष्यामि प्रत्यंगिरां
सुभाषितां दिव्यैर्मंत्रपदैर्भिन्नैः सुखोपायैः सुखप्रदैः ३३ पश्चाद्ब्र
ह्मा विधानेन मंत्रराजः प्रकीर्त्तितः अथातो मंत्रपदानि प्रवंति ॐ न
मः सूर्येक्षणाय अनिरुद्ध रूपाय पुरुहूताय महामरलाय महाव्यापिने
महेश्वराय जगच्छांतिकारिणे शांतार्थी सर्वव्यापिने महाघोरातिघो
राय ॐ प्रभावं दर्शय २ ॐ हिलि २ ॐ मिलि ॐ भूरि २ ॐ विद्युज्जिह्व २
ॐ ज्वल २ ॐ प्रज्वल २ ॐ मथ २ ॐ प्रमथ २ ॐ ध्वंसय २ ॐ विध्वंसय

प्र॰ ॐठः ॐठः ममशत्रूणां मुखं स्तंभय २ ॐयः ॐयः ॐठः ॐठः ममशत्रूणां
६ दंतान् स्तंभय २ ॐयः ॐयः ॐठः ममशत्रूणां जिह्वां स्तंभय २ ॐयः ॐ
यः ॐठः ॐठः ममशत्रूणां हृदयं स्तंभय २ ॐयः ॐयः ॐठः ॐठः मम
शत्रूणां हस्तौ स्तंभय २ ॐयः ॐयः ॐठः ॐठः ममशत्रूणां पादौ स्तंभ
य २ ॐयः ॐयः ॐठः ॐठः ममशत्रूणां गुह्यं स्तंभय २ ॐयः ॐयः ॐठः
6 ॐठः ममशत्रूणां इंद्रियाणि स्तंभय २ ॐयः ॐयः ॐठः ॐठः ममशत्रू
णां कुटुंबानि स्तंभय २ ॐयः ॐयः ॐठः ॐठः ग्रामं कीलय २ ॐ स्वा शिवः

कपालान्ग्रहांश्चस्तंभयर ॐयेचममधारकस्यसपरिवारकस्य
शत्रवःतान्निकृंतयर ॐयेचसदाममादिशाक र्मकुर्वंतिकारयंति
वानेमां अविद्यांस्तंभयर ॐस्थानंकीलयर ॐबुद्धिंघातयर ॐग्रामं
घातयर ॐरोमंकीलयर ॐविश्वमूर्त्तयेमहातेजसेस्वाहा ॐयः
ॐयःॐठःॐठः ममशत्रूणांविद्यांस्तंभयर ॐयःॐयःॐठःॐठःम
मशत्रूणां शिरस्तंभयर ॐयःॐयःॐठःॐठः ममशत्रूणांनेत्रेस्तंभ
यर ॐयःॐयःॐठःॐठः ममशत्रूणांकर्णौस्तंभयस्तंभय ॐयःॐसः

प्र. स्वड्गांगधारिणिममधारकस्यसपरिवारकस्यशत्रून्ॐछेदय२ॐ
७ दह२ॐहन२ॐपच२ॐमिथ२ॐधम२ॐप्रमथ२ॐसर्वदुष्टान्ग्र
स२ॐॐॐह्रूंदंष्ट्राकरालिनिममकृतेयंत्रमंत्रविषचूर्णशस्त्राभिचा
रसर्वोपद्रवादिकंयेनकृतंकारितंकुरुतेकारयतिवाकरिष्यतेकार
यिष्यनेवातान्सर्वान्ॐहन२ॐपच२ॐमथ२ॐप्रसंगिरेरक्ष२ॐ
7 तेमांसाधकंसपरिवारकंरक्ष२स्वाहा ॐऐंस्फ्रेंस्फ्रेंल्कं्ल्कं फट्स्वा
हा ॐऐंह्रींश्रींब्रह्माणिममशिरोरक्ष२स्वाहा ॐऐंह्रींश्रींमाहे त्रिपु:

नंकीलय २ ॐ मंडलंकीलय २ ॐ प्राणान्स्तंभय २ ॐ सर्वसिद्धिम
हाभागे ममधारकस्य सपरिवारकस्य सर्वतो रक्षांकुरु कुरु स्वा
हा ॐ ॐ ह्रूं ह्रूं फट् फट् स्वाहा ॐ ॐ ॐ ॐ यं प रं प लं प वं प शं प षं प
सं प हं प ळं प क्षं प ह्रीं प क्लीं प ह्रूं प फट् स्वाहा ॐ प्रत्यंगिरे महाविद्ये
ममधारकस्य सपरिवारकस्य सर्वतः रक्षां कुरु २ फट् स्वाहा ॐ यः
ॐ यः ॐ ठः ॐ ठः ॐ ॐ ह्रीं ह्रीं फट् स्वाहा ॐ भगवति दुष्टचारिणि त्रिशू
लधारिणि वज्रांकुशशक्तिधारिणि रुधिरमांसभक्षिणि कपाल

प्र· ८ णीतथा जृंभिणीभ्रामिणीरौद्रीतथासंहारिणीतिच शक्तयः
क्रमयोगेनशत्रुपक्षेनियोजिताः धारितासाधकेंद्रेणसर्वशत्रु
विनाशिनी ॐस्तंभिनि स्फ्रें स्फ्रेंममशत्रून्स्तंभय २ ॐमोहिनि
स्फ्रें स्फ्रेंममशत्रून्मोहय२ ॐक्षोभिणि स्फ्रें स्फ्रेंममशत्रून्क्षो
भय२ ॐद्राविणि स्फ्रें स्फ्रें ममशत्रून्द्रावयद्रावय ॐजृंभिने
स्फ्रें स्फ्रेंममशत्रूञ्जृंभय२ ॐभ्रामिणि स्फ्रें स्फ्रेंममशत्रून्
भ्रामय२ ॐरौद्रि स्फ्रें स्फ्रेंममशत्रून्रोदय२ ॐसंहारिणि शिवः

श्वरि मम नेत्रे रक्ष २ स्वाहा ॥ ॐ ऐं ह्रीं श्रीं कौमारि मम वक्त्रं रक्ष २ स्वाहा
ॐ ऐं ह्रीं श्रीं वैष्णवि मम कंठं रक्ष २ स्वाहा ॐ ऐं ह्रीं श्रीं वाराहि म
म हृदयं रक्ष २ स्वाहा ॐ ऐं ह्रीं श्रीं नारसिंहि मम बाहू रक्ष २ स्वाहा
ॐ ऐं ह्रीं श्रीं इंद्राणि मम नाभिं रक्ष २ स्वाहा ॐ ऐं ह्रीं श्रीं चामुंडे मम
गुह्यं रक्ष २ स्वाहा ॐ ऐं ह्रीं श्रीं चंडिके मम जंघे रक्ष २ स्वाहा ॐ
ऐं ह्रीं श्रीं वसुंधरे मम पादौ रक्ष २ स्वाहा ॐ ऐं ह्रीं श्रीं स्फें ह्रूं ह्रूं प्रत्यं
गिरे मम गात्रं रक्ष २ स्वाहा ॐ स्तंभिनी मोहिनी चैव क्षोभिणी द्रावि

स्फ्रें स्फ्रें ममशत्रून्संहर २ यइमांधारयेद्विद्यांत्रिसंध्यंवास्म
रेदपि सोपिदुःखवात्तकोभूत्वाहन्याच्छत्रूनन्नसंशयः सर्वतो
धारयेद्विद्यांमहाभयविपत्तिषु महाभयेषुघोरेषुनभयंवि
द्यतेक्कचित् सर्वान्कामानवाप्नोतिमर्त्योदेविनसंशयः कू
टस्थंकुकुरस्तोद्दिक्षुमायाबीजंचपंचकं फट्कारेणसमोपे
तंरक्षयेत्साधकोत्तमं ॐॐहूंहूंह्रींह्रींप्रसंगिरेस्फ्रेंस्फ्रेंविकट
9 दंष्ट्रेह्रींह्रींकालिकेस्फ्रेंस्फ्रेंविकटदंष्ट्रेह्रींह्रींकालिस्फ्रेंस्फ्रेंका

रिपिममशत्रून्ॐछेदय२ॐखादयॐसर्वदुष्टान्मारयरत
ड्डेनॐछिंद्धि२ॐभिंद्धि२ॐचिकि२ॐपिब२ॐरुधिरंस्फें
स्फेंॐकिवि२ॐकालिकालिमहाकालिॐश्रींह्रींह्रांह्रूंफट्स्वा
हा अष्टोत्तरशतंजप्त्वासाक्षात्सिद्धीश्वरोभवेत् ॥ ऋषिरस्तुभैर
वोनामछंदोनुष्टुप्प्रकीर्तितं देवताकोशिकीप्रोक्तानाममस्य
गिरेवच कूर्चबीजैःषडंगानिकल्पयेत्साधकोत्तमः सर्वोत्कृ
ष्टोपचारैस्तुध्यायेत्सत्यंगिरांसुभां ॐध्यैकपालंडमरुंत्रिशूल शिवः

त्वंसंबिभ्रतीचंद्रकलावतंसं पिंगोर्ध्वकेशी।सितभीमदंष्ट्राभू
याद्विभूत्यैममकामदाध्ये एवंध्यात्वाजपेन्मंत्रमेकविंशत्ति
वासरं शत्रून्सनाशयत्येवप्रकारोयंसुनिश्चितः अथाष्ट
म्यांमध्यरात्रौशरत्कालेमहानिशि आराधिताचसाविद्या
तत्क्षणात्सिद्धिदाभवेत् सर्वोपहारसंपन्नरक्तवस्त्रफलादि
भिः पुष्पैःसुरत्नवर्णैश्चतसाधयेत्कालिकांपरां वर्षादूर्ध्वम
10 जंमेषंमृगंवाविधिवद्बलि मरीचभ्यजालवणसर्षपैर्मारणं

प्र. भवेत् महासंकष्टरोगोचनभयंविद्यातेकचित् प्रेतपिंडंसमादाय
१० गोलकंकारयेत्ततः मध्येनामांकितांकृत्वाशत्रुमयींचपुत्तलीं
जीवंतत्रविधायैवचितान्मौप्रक्षिपेत्ततः एकायुतंजपंकृत्वात्रिरा
त्रान्मरणंरिपोः महाज्वरोभवेत्तस्यतप्तताम्रशलाकया यद्वा
रेखाविन्यस्यसप्ताहान्मरणंरिपोः इतिश्रीचंडेश्वरशूलपाणि
महातंत्राद्विनिर्गतगौरीसंवादेप्रत्यंगिरीस्तोत्रंसंपूर्णम् ॥ ॥

शिवः